श्री रणवीर-केन्द्रीय-संस्कृत-विद्यापीठम्

काश्मीर-शैवदर्शन-विभाग:

प्रवेश संख्या -72--- विषय :-शैवदर्शनम् क्रम सं. -35---

नाम --परमार्थसारटीका- ग्रन्थकार नाम -राजानकयोगराज

पत्र सं. -65--- अक्षर सं. (पंक्तौ) शब्द---6-- पंक्ति सं. (पृष्ठे)-17,-18

आकार: 6" X 7.8." ---- लिपि: -शारदा-- आधार: ----कागज--

वि. विवरणम् -पू.---------

पर्यवेक्षक :------------ दिनांक: --16-9-2000.

52.

M.K. Marwaha

7

72

परमार्थसार - टीका

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥ ० ॥ [illegible]
[illegible]
[illegible]

[illegible]
[illegible] १ ॥
[illegible]
[illegible] २ ॥
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥ १ ॥ [illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥ १ ॥ [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] —

[illegible] ।

[illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

कल्पे विहीनमपगतस्थितिभङ्गवत्वं परं तत्त्वमेवैक-
रूपमिति विमलं विकल्पमलरहितं समस्तमलरहितं चैतन्य-
रूपं तथा सत्त्वमिति पदक्रममन्त्रादिभेदेन व्यक्ति-
ममायोगेन अध्युपायं न यत्र गम्यं सकलकल्पे महाप्र-
लयेऽप्यविहीनमिति 'महाप्रलयेऽप्यमन्दः' इत्युक्त-
मनुत्तर एव सर्वोत्कृष्टत्वेन विश्वरूपमनवधः कल्प
न क्षमते यतः कल्पसृष्ट्याद्यनवच्छिन्नम् इति सम्यग्वि-
वितं मया विश्वं परस्य स्वरूपाणि विश्वस्य विश्वरूपतय-
मिति कुलिशमिति स्फुरत् ॥११॥ ननु एवं विश्वं पर-
स्मात् तत्त्वात् इति यदुच्यते भिन्नं स्फुरति तत्त्वं पर-
स्वरूपतया न किञ्चिद् [illegible] इति भिन्नं
[illegible] इति कथं वा [illegible] स्फु-
रति [illegible] —

दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि।
भाति विभागेनैव च परस्परं दर्पणादपि च ॥१२॥
विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि।
अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत् ॥१३

[illegible]

[illegible]

[illegible]
कारिकाभिः प्रतिपादयति —
शिवशक्तिमयः [illegible]
[illegible] ॥ [illegible] ॥
[illegible] परमशिवः [illegible]
[illegible]

५१

[illegible]

[illegible]

सीति वमनमन्त्रविदां विमलत्वमङ्कुरयति कश्चित्-
यत्वं विषयस्तीक्ष्णत्वेन स मन्त्रेभि कथयतीत्यर्थः-
त्वमपत्रमाङ्कुरयतीति ।२९॥ एवं मन्त्रसिद्धिवि-
षयस्वरूपं कथयति —
एवं गूढे विषयः शुक्रः भूमितलपतितो यः श्रोतुं
उत्तरपादाङ्कं उत्तमः सिद्धे भवेत् स गुरुः ॥ ३० ॥
यक्तव्यश्रीकरः य एवं भिन्नस्य त्वं विषय-
योगः श्रोतुं सकलमन्त्रः भूमितलपतितः विशेषेण ग-
तिमान् समस्तार्थप्रवर्तकः ... उक्तेव मन्त्रसि-
द्धिस्वरूपं उत्तमं मन्त्रसम्पन्नं मन्त्रोत्तमं सिद्धिप्रद-
ति विषयविषयिणः परस्पर योगिनां भिन्नस्य वति-
स्वमपि उत्तरपादाङ्कमाङ्कुरयतीति ॥३०॥ विष-
यत्वं परस्परसंयोगः पाशबद्धमीति कथयति —
एतस्मिन् मन्त्रमूले विषयस्तु रूपपादाङ्कतः ।
रहेऽपि नरः पवनभुक्तः अनिलं स पक्षी स ॥ ३१
एतस्मिन् मन्त्रमूलं मन्त्रसिद्धं स्वरूपे विशेषे :
मूले विषयः स एव रूपस्वरूपं यतः उत्तमः मन्त्रसि-
द्धिस्वरूपं विशेषेण नरः पवनः मन्त्रसिद्धः पवनः रूपसं-
युक्तः सन् स्वयं पक्षी, एवं स्वयंपूर्णस्य रूपः रूपसं-
युक्तस्य पक्षी, इति पवनभक्षणत्वेन, कश्चित्-

पृ.
ली.
०१

[illegible]
[illegible]
[illegible] ॥११
[illegible]
[illegible]
[illegible] ॥१२॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ।१३।
[illegible]
[illegible]
[illegible] ॥१८॥
५८ [illegible]
[illegible]

𑆟𑆩𑆳𑆲𑆁 𑆥𑆷𑆫𑇀𑆟𑆩𑇀𑆩𑆤𑇀𑆪𑆠𑆳 𑆩𑆴 𑆮𑆴𑆘𑇀𑆚𑆳𑆤𑆳𑆑𑆬𑆥𑆑𑇀𑆰𑆼 𑆥𑇀𑆫𑆬𑆪𑆳𑆑𑆬
𑆓𑆠𑆳 𑆱𑇀𑆪 𑆠𑆠𑇀𑆠𑇀𑆮𑆱𑇀𑆪 𑆑𑆫𑇀𑆩𑆑𑆠𑇀𑆮𑆼 𑆱𑆠𑆾 𑆱𑇀𑆪 𑆥𑆷𑆫𑇀𑆟𑆠𑇀𑆮𑆳𑆨𑆴-
𑆩𑆳𑆤𑆾 𑆪𑆼𑆤 𑆨𑆴𑆤𑇀𑆤𑆩𑆳𑆪𑆵𑆪𑆳𑆢𑇀𑆪𑆫𑇀𑆡𑆠𑆠𑇀𑆮𑆳𑆨𑆴𑆩𑆳𑆤𑆾 𑆪𑆁 𑆩𑆳𑆪𑆵-
𑆪𑆾 𑆩𑆬𑆂𑇅 𑆢𑇀𑆮𑆴𑆠𑆵𑆪𑆂 𑆑𑆫𑇀𑆩𑆳𑆥𑆼𑆑𑇀𑆰𑆪𑆳 𑆥𑆷𑆫𑇀𑆟𑆠𑆳𑆱𑆁𑆥𑆳𑆢𑆤𑆵𑆪𑆁 𑆯𑆷𑆤𑇀𑆪𑆴𑆑𑆁 𑆱-
𑆫𑇀𑆮𑆩𑆼𑆮𑆳𑆤𑆳𑆁 𑆨𑆳𑆮𑆳𑆤𑆳𑆁 𑆯𑆷𑆤𑇀𑆪𑆁 𑆢𑆸𑆯𑇀𑆪𑆩𑆳𑆱𑆴𑆠𑇀𑆪𑆼𑆮𑆁𑇅 𑆋𑆮
𑆠𑆸𑆠𑆵𑆪𑆂 𑆑𑆳𑆫𑇀𑆩𑆾 𑆩𑆬𑆂 𑆪𑆼𑆤 𑆯𑆶𑆨𑆳𑆯𑆶𑆨𑆑𑆫𑇀𑆩𑆨𑆾𑆓𑇀𑆪𑆠𑇀𑆮-
𑆬𑆑𑇀𑆰𑆟𑆁 𑆨𑆮𑆠𑆴𑇅 𑆋𑆮𑆩𑆤𑆼𑆤 𑆥𑆳𑆯𑆮𑆩𑆬𑆠𑇀𑆫𑆪𑆼𑆟 𑆑𑆫𑇀𑆩𑆠𑇀𑆫𑆪𑆼𑆟
𑆮𑆴𑆯𑇀𑆮𑆁 𑆮𑆴𑆑𑆫𑇀𑆰𑆁 𑆥𑆴 𑆪𑆼 𑆑𑆫𑇀𑆩𑆮𑆯𑆳𑆢𑆴𑆠𑆴 𑆱𑆁𑆱𑆳𑆫𑆪𑆠𑆴
𑆱𑆁𑆱𑆫𑆠𑆴 𑆥𑆯𑆶𑆫𑆴𑆠𑇀𑆪𑆶𑆓𑇀𑆪𑆠𑆼 𑇆𑇓𑇘𑇆 𑆋𑆠𑆢𑇀𑆮𑆴𑆫𑆶𑆢𑇀𑆣𑆩𑆥𑆴 𑆱𑆶𑆠𑆫𑆳𑆁 𑆱𑆁
𑆨𑆮𑆠𑆵𑆠𑇀𑆪𑆳𑆲 —

𑆱𑆁𑆱𑇀𑆑𑆳𑆫𑆳𑆠𑇀𑆪𑆴𑆨𑆴𑆫𑇀𑆪𑆾𑆓𑆳𑆢𑆼𑆑𑆩𑆥𑆴 𑆱𑆁 𑆱𑆶𑆑𑆮𑆩𑆁𑆯𑆤𑆩𑇀
𑆓𑆸𑆲𑆤𑇀𑆠𑆴 𑆑𑆼𑆮𑆬𑆳𑆤𑇀𑆪𑆼𑆮 𑆥𑆼𑆯𑆴𑆢𑇀𑆣𑇀𑆪𑆼 𑆓𑆸𑆲𑇀𑆤𑆷𑆠𑆼 𑇆 𑇓𑇙 𑆓𑇀𑆫𑆷

𑆋𑆰 𑆑𑆫𑇀𑆩𑆠𑇀𑆫𑆪𑆩𑆱𑇀𑆠𑆶 𑆠𑆢𑇀 𑆯𑆶𑆢𑇀𑆣𑆩𑇀 𑆪𑆼𑆤𑆼𑆠𑆶𑆑𑆳𑆩𑆱𑇀𑆠𑆶 𑆢𑆼𑆑-
𑆩𑆥𑆴 𑆱𑆁𑆱𑇀𑆑𑆫𑆩𑆥𑆴 𑆱𑆁 𑆥𑆴𑆟𑇀𑆝𑆁 𑆤𑆤𑇀𑆢𑆱𑆤𑇀𑆠𑆶𑆥𑆤𑆠𑆩𑆱𑇀𑆠-
𑆱𑆶𑆑𑆮𑆁 𑆱𑆼𑆠𑆼𑆩𑆱𑇀𑆠𑆩𑆱𑇀𑆠𑆫𑆳𑆁 𑆱𑆶𑆥𑆁 𑆱𑆩𑆱𑇀𑆠𑆱𑆩𑆱𑇀𑆠-
𑆩𑆴𑆤𑇀𑆤𑆳𑆤𑆪𑆩𑆳𑆤𑆱𑇀𑆮𑆥𑆳𑆑𑇀𑆰𑆴𑆠𑆾 𑆱𑆳𑆤𑆠𑆴 𑆱𑆑𑆼𑆢 𑆮𑆴𑆥𑆫𑆵𑆠𑆼𑆤
𑆑𑆼𑆮𑆬𑆼𑆤 𑆩𑆱𑇀𑆠𑆶𑆠𑆴 𑆯𑆴𑆪𑆠𑆼 𑆪𑆡𑆳 𑆓𑆼𑆥𑆳𑆠𑇀𑆪𑆴𑆨𑆴𑆫𑇀𑆪𑆥𑆢𑆠𑆂
𑆥𑆾 𑆯𑆵 𑆱𑆶𑆑𑆮𑆳𑆢𑆴𑆑𑆩𑆥𑆴 𑆩𑆑𑆱𑆥𑆳𑆤𑆩𑇀 𑆠𑆼𑆩𑆑𑆮𑆴𑆩𑆼 𑆤𑆑𑆩𑆴𑆨𑆶𑆁-
𑇐𑇓 𑆠𑆴 𑆥𑆳𑆯𑆴𑆁𑆢𑆴𑆠𑆁 𑆯𑆼𑆑𑆩𑆥𑆴 𑆱𑆘𑆪𑆠𑆼 𑆠𑆼𑆩𑆑𑆮𑆴𑆩𑆼 𑆥𑆯𑆶𑆠𑆴

विमृष्टमिति वैशस्यमपि स्फुटम्ः सत्कृतमिति य-
थोक्तं 'यस्मात्सिद्धं हि वस्तु प्रकाशनात्म[illegible] स्थितिः,
सृष्टिसंहारकारिणे मूर्त्ये लोकत्रयाय नमः' इत्येवमादि,
एवमिति सत्ता सत्ताया [illegible] सत्यमेव वस्तु
परमार्थमिति वैशेषिकाद्ये [illegible], यत्र पिण्डः इति
चैतन्य एव परमार्थसत्यः नाभिमानत्वं नाम किञ्चिद्वि-
कल्पकरणस्य प्रकाशात् नाप्यपरत्व अपरिच्छिन्नत्व [illegible]
इति चैतन्यमेव चरमः पारमार्थः किं मामत्वेन-
ति नन्वपि तु विकल्पैः मानत्वं विवक्षमाण चैतन्य न-
त्वपि सर्वत्रापि न तथा इत्येवमादि [illegible]
[illegible] परमार्थ इति [illegible] इत्येवमादि [illegible] [illegible]
[illegible] स्वरूपमात्रमिति स-
[illegible] प्रकाशमानस्य वस्तुनो, न प्रकाशनीयत्व-
[illegible] प्रकाशमानेन परमार्थेन तु न [illegible]
[illegible] [illegible]
विद्यमान एव [illegible] एव परम प्रकाश परमार्थः स्व-
[illegible]
[illegible] प्रकाशमान [illegible]

'श्री[illegible] स्वभावतः [illegible] [illegible]
[illegible] भवति । [illegible] नाकि[illegible]
स केवलमयं विश्वं शिवमय' इति ॥३२॥ इत्य[illegible]
[illegible] निरूपणमाह —

[illegible] नास्ति [illegible] पदत्रयम् ।
[illegible] विषवत् मन्यते नाम ।३३।

[illegible] विषवत् मन्यते न केनापि [illegible]
[illegible] इति [illegible] । [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] इति [illegible] ॥ ३४

[illegible] —

पा: [illegible] ।
सी: [illegible] ॥ ३५
३०

[illegible]

'श्रीगङ्गाय च अनन्तः सुमनीषिकाद्दि सद्भुक्त्युद्भासि
यदुत्तमा वसति । तदुक्तमेव तपते ऽपि नाकिञ्चित्त्वं संस्
थ केवलभयं विद्धं विवद' इति ॥२१॥ इत्थं सु-
त्रसमस्त प्रतिपादनसमर्थेन नियमनमाह —
सर्वं नास्ति कुलसम्भूतं जगत्समस्तुपदत्वम् ।
सर्वमप्यशी मातृ न विवक्तुं सन्तो नम ।२२।
सत्त्वप्रकृष्टं प्रतिपाद्य यद्भूपप्रतिसमने मपटी
मातृसत्त्वं समस्तं न केन विवक्तुं सन्तो न केनापि-
मनयितुं पदतु इत्यर्थः । यथा वसुपतेन सल्लः पति-
सम्भवन मीयतज्ञ कुलिनीमुपकसमस्य भेदः य-
मिद चवसम्पत्त्य सत्स्वहै: च समस्तप्रतिभेदं मदप्र-
वसायः समस्तप्रतिसमस्तं मारवसायं विमलपि
मत्तत्वभिद्धमस्ति भूय कुतापि मद्भ्रम चीर-
लीयं वकं समस्तिप्र सत्तः सत्तिदकृ नामं के न-
मन यस्य इति विद्धम एव प्रकृतपक्षे देश्याति ॥ ४५
एतदुक्तं समन्वयते —
पु: उत्कर्षमसभात्रियेद्विभावभापकः एषः ।
सौ: [illegible]
१० वलसूमाधि मद्दवसाधि विद्दमवलप्रवति ॥ २४

सि[illegible]

एवं यथा [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥१७॥ [illegible]
[illegible]

[illegible] ।
[illegible] ।१८
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

॥ ३० ॥ [illegible]

[illegible] ॥ ३० ॥

[illegible]

१०

[illegible]

[illegible] ३०

[illegible]

[illegible] ॥ ३४ ॥

[illegible]

५
[illegible]
३३

[illegible]

[illegible]

[illegible] ॥३०॥ [illegible]

[illegible]

[illegible] इति परमशिवः ॥३३॥

[illegible]

[illegible]

स्पन्द इति । किमिति तद्वृत्ति भाग्वति स णावर्णिनः-
न इति तत्त्वमिति इति स्वरूपोपाधितया स्वभा-
णार्थस्तन्त्रः परमशिवः प्रकाशविमर्शनैकघन-
लक्षणः स्वरूपगोपनसमर्थः क्रीडाशीलत्वात्स्वे-
च्छयाद्यत्वं स्वरूपं मेव स्वातन्त्र्यप्रथनं वि-
धाय स्वरूपं सङ्कोच्य स तत्तु विसर्जयति उतैव परः
स्वशक्तिः स्वरूपसङ्कोचमय स्वभावं स्वातन्त्र्यप्र-
सरतत्त्वं निवर्त्य स एव तं स्वरूपं भोग्यतीकृत्य-
यथा तत्त्वमेकमिदं संसारपदेन स्वरूपस्वभावमयी
क्रीडां विलसं स्वरूपेति विश्वमयति एकधीन
रमस्वरूपमिति स्वरूप एवैष विश्व यत्तं स्वभाव-
स्वरूप पञ्चः स्वरूपरूपः सञ्चरन्नन्तर्विश्वरूप स्व-
रूपेणैव स्वतन्त्रम् ॥३४॥ न केवलमीदृ-
शमयः कश्चिदवस्थाविशेषः स्वभिन्नोऽपि विमृत-
एव तत्स्वरूपेण तावत् स्फुरति —

पं॰
स्पं॰
टी॰
१८

𑆱𑆫𑇀𑆮𑆯𑆑𑇀𑆠𑆴𑆱𑆁𑆖𑆳𑆫 𑆍𑆮𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆼 𑆱𑇀𑆮𑆱𑇀𑆮-
𑆅𑆠𑆴 𑆠𑆱𑇀𑆩𑆴𑆤𑇀 𑇅 𑆅𑆠𑆴 𑆠𑆶𑆫𑆵𑆪 𑆱𑇀𑆮𑆨𑆳-
𑆮𑆼 𑆠𑆠𑇀𑆫𑆳𑆥𑆴 𑆠𑆼𑆘𑆾𑆫𑆷𑆥𑆁 𑆅𑆠𑆴 𑇆 𑇓𑇓

𑆮𑆴𑆔𑇀𑆤𑆥𑆑𑇀𑆰𑆳𑆪 𑆪𑆼 𑆱𑆠𑇀𑆠 𑆱𑆫𑇀𑆮𑆼 𑆱𑆫𑇀𑆮𑆥𑆶𑆩𑆫𑇀𑆠𑇀𑆪𑆤𑆱𑇀𑆠𑇀𑆫 𑆪𑆼
𑆍𑆮𑆩𑆶𑆑𑇀𑆠𑆼𑆥𑇀𑆪𑆼𑆰𑆶 𑆮𑆴𑆯𑆼𑆰𑆥𑇀𑆫𑆱𑆶 𑆠𑆠𑇀𑆥𑆫𑇀𑆪 𑆍𑆠𑆱𑇀𑆩𑆴𑆤𑇀𑆑-
𑆬𑆼 𑆥𑆶𑆤𑆯𑇀𑆖 𑆪𑆠𑇀 𑆠𑆶𑆫𑆵𑆪 𑆱𑇀𑆮𑆨𑆳𑆤𑆼 𑆱𑆠𑇀𑆪𑆶 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰-
𑆩𑆪𑆼 𑆥𑆫𑆁 𑆅𑆠𑆴 𑆠𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆠𑆂 𑆱𑆠𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑆁𑆑𑆬𑇀𑆥-
𑆠𑆱𑇀𑆩𑆳𑆠𑇀 𑆥𑆑𑇀𑆰𑆳𑆪 𑆓𑆠𑇀𑆮𑆳𑆠𑇀𑆫𑆪 𑆤𑆱𑇀𑆠𑆴 𑇅 𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆼𑆠𑆴
𑆪𑆠𑇀𑆫 𑆱𑇀𑆮𑆑𑆫𑇀𑆩𑆠𑆂 𑆠𑆠𑇀𑆫 𑆠𑆠𑇀𑆫𑆳𑆥𑆴 𑆱 𑆱𑇀𑆮𑆑𑆫𑇀𑆩𑆠𑆂 𑆱𑇀𑆮𑆠𑆂
'𑆯𑆴𑆮 𑆱𑆠𑇀𑆪𑆁 𑆠𑆼𑆘𑆱𑇀𑆮𑆫𑆷𑆥𑆩𑆼' 𑆅𑆠𑆴 𑆱𑇀𑆮𑆱𑇀𑆮𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆪
𑆠𑆶𑆫𑆵𑆪𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆠𑆁 𑆱𑆼𑆠𑆶𑆤 𑆅𑆠𑇀𑆪𑆳𑆅𑆠𑆴 𑆥𑆫𑆩𑆂 𑇅 𑆍𑆠-
𑆠𑆠𑇀 𑆠𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑆁𑆑𑆬𑇀𑆥𑆁 𑆱𑆫𑇀𑆮𑆮𑆼𑆢𑆤 𑆠𑆠𑇀𑆫𑆳𑆥𑆴 𑆠𑆼-
𑆘𑆾𑆫𑆷𑆥𑆁 𑆅𑆠𑆵𑆠𑆴 𑆠𑆤𑇀𑆩𑆳𑆥𑆴 𑆠𑆼𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆪𑆳𑆥𑇀𑆪𑆠𑆱𑆩-
𑆥𑆴 𑆠𑆼𑆘𑆂 𑆱𑆩𑆠𑆵𑆤𑇀𑆢𑇀𑆪𑆠𑆪𑆳 𑆱𑆮𑆼𑆤𑆢𑇀𑆪𑆠𑆪𑆳 𑆱𑆮𑆫-
𑆮𑆫𑇀𑆩𑆠𑆼 𑆍𑆮 𑆤𑆪𑆤𑆱𑆷𑆩𑆮𑆳𑆬𑆼𑆤 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆠𑆠𑇀
𑆠𑆼𑆤𑆼𑆠𑆶 𑆅𑆠𑆴 𑆮𑆴𑆮𑆫𑆟𑆩𑇀 𑆱𑆮𑆱𑇀𑆮𑆫𑆷𑆥𑆱𑇀𑆪𑆳𑆥𑆴 𑆱𑆩𑆼𑆮
𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆩𑇀

वैमल्ये च यथा [illegible] लीनं स्वयं तु स्वरूपं [illegible]-
[illegible] ततः परं [illegible] -

एवमिदं [illegible] प्रमूलः प्रकृतिम-
[illegible] । बुद्धिः [illegible] ज्ञान ध्यान-
[illegible] तः परं [illegible] ॥ ३८ ॥

एवमेवमेव [illegible] स्वरूपं [illegible]-
[illegible] विषय [illegible] परमेश्व-
[illegible] प्रकाश [illegible] प्रवाह-
[illegible] विषय विषयित्वेन [illegible]
[illegible] एव [illegible]
[illegible] विद्यते [illegible]-
[illegible] विषये [illegible]
[illegible] । [illegible]
प॰ [illegible] एकः [illegible] । [illegible]
सा॰ [illegible]
टी॰ [illegible] प्रकृतिमहत्त्व [illegible]
३५

सूत्रे रविचन्द्राग्नि सद्भावे विषये ऽयत्र पुनरुक्ते
नापि तद्रहितं सद्भावादिकं नाम किञ्चिद्यामलस-
स्तीति । नापि रहस्यार्थवसामर्थ्यमेव हि किञ्चि-
च्छिवशक्तिर्वा कालाग्निरुद्रपर्यन्तं । यतो विमर्श-
सत्त्वं वेदयन्ति ततः सूत्रे सर्वं प्रकाशते ततः-
प्रभृति रसायनम् । यत एव तत एव तत्त्वैक-
त्वेन तत्त्वं सर्वं विश्वः सूत्रे यतः सूक्ष्म-
मेव प्रकाश सूत्रं तत्र तत्त्वान्तरे सर्वकल्प-
नाशैर्विशुद्धरूपत्वात् प्रविशन्ति प्रतिपत्तिसूत्रे, स-
र्वात्मैव विश्वं प्रकाशयति, सूक्ष्मः सूत्रं
सूत्र एव सूक्ष्मरूपमिति तत्स्वरूपम् । यतो वक्ष्यते ऽपि-
तत्त्वं 'प्रविशन्ति तन्मयं सर्वं तत्रैव प्रलीय-
न्ते ।' सर्वज्ञः सर्वगतः सूत्रे तेजः प्रकाशते ॥ इ-
ति प्रकाशमात्रमेवेदं विश्वं सूत्रे सूक्ष्म-
त्वेन स्थितं । तत्र सूक्ष्मः सूत्रं वर्तते सर्वप्र-
काशे ऽयं सर्वात्मा सर्वं स सूक्ष्मो ऽस्ति सूक्ष्म-

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥ ३५ ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] परमेष्ठी [illegible]

[illegible]

[illegible]

[illegible]

पं. मं. ली. ३१ [illegible]

[illegible]

[illegible]

𑆢𑇀𑆫𑆸𑆯𑇀𑆛𑆑𑆤𑆴𑆪𑆮𑇀𑆫𑆴𑆠𑆼, 𑆘𑆵𑆮𑆼 𑆤𑆴𑆘𑆠𑆶 𑆅𑆠𑇀𑆪𑆥𑆴 𑆥𑆫𑆩𑆳𑆠𑇀𑆩𑆤𑆴
𑆨𑆳𑆱𑆴𑆠𑇀𑆠𑆸 𑇆 𑆇𑆑𑇀𑆠𑆩𑆼𑆮 𑆇𑆥𑆢𑇀𑆫𑆸𑆯𑇀𑆛𑆳𑆤𑇀𑆠𑆁 𑆨𑆷𑆬𑆼𑆤 𑆪𑆠𑇀𑆤𑆼𑆠𑆴 𑇆𑇓𑇗𑇆
𑆤𑆤𑇀𑆮𑆼𑆑𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆥𑆴 𑆥𑆫𑆩𑆳𑆠𑇀𑆩𑆤𑆴 𑆪𑆢𑆴 𑆨𑆮𑆠𑆳 𑆮𑆴𑆩𑆴𑆯𑇀𑆫𑆾 𑆨𑆳𑆮-
𑆑𑆂 𑆥𑆫𑆴𑆖𑇀𑆗𑆼𑆢𑆑𑆩𑆳𑆤𑆁 𑆠𑆢𑆳 𑆘𑆵𑆮𑆳𑆤𑆳𑆁 𑆖 𑆧𑆢𑇀𑆣𑆾𑇀𑆥𑆴 𑆩𑆴𑆯𑇀𑆫𑆑𑆠𑆳𑆪𑆳𑆁 𑆱𑆴-
𑆢𑇀𑆣𑆴 𑆑𑆡𑆩𑆼𑆠𑆢𑆴𑆠𑇀𑆪𑆳𑆯𑆓𑇀𑆑𑇀𑆪𑆳𑆲 —

𑆍𑆑𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆼𑆮 𑆓𑆓𑆤𑆼 𑆫𑆘𑆾𑆣𑆷𑆩𑆳𑆢𑇀𑆪𑆶𑆥𑆥𑇀𑆬𑆮𑆼 𑆨𑆮𑆤𑇀𑆠𑆴
𑆤𑆳𑆤𑇀𑆪𑆳𑆤𑆴, 𑆩𑆬𑆴𑆤𑆳𑆤𑆴 𑆱𑇀𑆪𑆶𑆱𑇀𑆠𑆢𑇀𑆮𑆘𑇀𑆘𑆵𑆮𑆂
𑆨𑆳𑆮𑆑𑆂 𑆥𑆫𑆴𑆖𑇀𑆗𑆼𑆢𑆂 𑇆 𑇓𑇘 𑇆

𑆪𑆡𑆽𑆑𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆼𑆮 𑆓𑆓𑆤𑆼 𑆣𑆷𑆬𑆴𑆣𑆷𑆩𑆳𑆨𑇀𑆫𑆑𑆬𑆶𑆰𑆴𑆠𑆼 𑆤-
𑆤𑇀𑆪𑆳𑆤𑆴 𑆘𑆛𑆳𑆑𑆳𑆯𑆳𑆤𑆴 𑆮𑆴𑆩𑆬𑆳𑆤𑇀𑆪𑆥𑆴 𑆠𑆠𑇀𑆱𑆩𑇀𑆧𑆤𑇀𑆣𑆮𑆴𑆩-
𑆬𑆩𑆬𑆴𑆤𑆳𑆤𑆴 𑆣𑆷𑆩𑆳𑆨𑇀𑆫𑆑𑆬𑆶𑆰𑆴𑆠𑆳𑆤𑆴 𑆨𑆮𑆤𑇀𑆠𑆴, 𑆮𑆴𑆩𑆬𑆁
𑆫𑆷𑆥𑆑𑆁 𑆤𑆴𑆫𑇀𑆩𑆬𑆩𑆥𑆴 𑆓𑆓𑆤𑆁 𑆘𑆛𑆳𑆑𑆳𑆯𑆁 𑆘𑆛𑆳𑆑𑆳𑆯𑆨𑆼- 𑆩𑆼
𑆢𑆁 𑆨𑆮𑆠𑇀𑆪𑆳𑆠𑇀𑆩𑆩𑆼𑆮 𑆇𑆥𑆽𑆮 𑆘𑆛𑆳𑆑𑆳𑆯𑆁 𑆇𑆥𑆳𑆣𑆴𑆨𑆴𑆂 𑆤 𑆨𑆮𑆠𑆂
𑆨𑆮𑆤𑇀𑆠𑆴 𑆘𑆛𑆳𑆑𑆳𑆯𑆳𑆤𑆴 𑆣𑆷𑆬𑆣𑆷𑆩𑆳𑆢𑇀𑆪𑆶𑆥𑆲𑆠𑆳𑆤𑆴 𑆨𑆳-
𑆱𑆩𑆳𑆤𑆳𑆤𑆴 𑆨𑆮𑆤𑇀𑆠𑆴 𑆮𑆴𑆮𑆴𑆣𑆩𑆬𑆵𑆤𑆳𑆤𑆴 𑆍𑆑𑆩𑆼𑆮-
𑆮𑇀𑆪𑆳𑆥𑆑𑆁 𑆑𑆵𑆢𑇀𑆫𑆯𑆁 𑆘𑆛𑆳𑆑𑆳𑆯𑆮𑆴𑆩𑆬𑆩𑆱𑇀𑆠𑆶 𑆨𑆮-
𑆠𑆴 𑆑𑆱𑇀𑆪𑆳𑆥𑆴 𑆓𑆓𑆤𑆁 𑆮𑆳𑆨𑆮𑆠𑇀 𑆘𑆛𑆳𑆑𑆳𑆯𑆂 𑆘𑆛𑆳𑆑𑆳𑆯𑆠𑆴-

[illegible]

[illegible]

इत्यनुभवितस्मरणद्वन्द्वत्वं इत्यनन्तरं परा-
मर्शैव श्रद्धमतिस्मरणेनैव विनाशयतीति ना-
श्रयत्वमाहात्म्यं । ३७ । एवं हृत्तिद्वयापसार-
णद्वारेणान्तरीकृत्य योगिनो न किञ्चिद्दुर्लभमित्यु-
पसंहरति —

ॐ विघ्नमयुगलकमलं विमृशन्नेन्-
द्रजालं । क्षपयन्तरकलनं ... न परा-
योगिनो भवति ॥ ३८ ।

ॐ ... हृत्तिद्वयस्य
... पारिप्लवस्य
... भूयः ...
... न ...
...
...
... पारमेश्वर्यं योगिनः ...

[illegible] । ८० । ॥

[illegible]

[illegible] । ८० ।

प. मं. ली. ३. [illegible] ॥ [illegible]

[illegible]
[illegible]
[illegible]
[illegible] ॥

[illegible]
[illegible]
[illegible] ॥

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥

[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥

कलशम्। तथाऽहं भक्तं मन्ये विघ्नहरि च-
न्द्रचूडामणिम्। ॥ ८३॥

ऽस्मिन्नुक्त भवत्सक्तं मत्वं [illegible] यतः तत्र-
विदः 'भवत्येव [illegible] भवति' इति [illegible]
[illegible] वदति पद्मासनस्य तत्र
[illegible] 'भक्ते-
[illegible] विकल्पः'
इति [illegible]
'भक्तं [illegible] इति [illegible]
[illegible] इति 'यतः [illegible]
[illegible] इति [illegible]
[illegible] भक्तं [illegible]
[illegible]
नः' इति [illegible] मन्ये
विघ्नहरि '[illegible]' इति
[illegible]
[illegible]

पं॰ सं॰ ली॰ ३०

[illegible] ।८३। [illegible]

[illegible]

[illegible]

[illegible]

[illegible] |[illegible]|
[illegible]
[illegible] —
[illegible]
[illegible]
[illegible] |[illegible]|
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

𑆮𑆼𑆠𑇀𑆠𑆴𑆂 𑆠𑆢𑆼𑆮𑆁 𑆮𑆴𑆩𑆫𑇀𑆯𑆮𑆸𑆠𑇀𑆠𑆴𑆩𑆴𑆠𑆴 𑇅 𑇘𑇕 𑇅
𑆍𑆮𑆩𑆴𑆪𑆠𑆳 𑆠𑆼𑆤𑆼𑆢𑆸𑆯𑆼 𑆘𑆓𑆢𑆶𑆥𑆩𑆫𑇀𑆢𑆼 𑆱𑆠𑆴 𑆠𑆼𑆤 𑆠𑆼𑆤 𑆱𑇀𑆮-
𑆫𑆷𑆥𑆠𑆪𑆳 𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆼𑆟 𑆯𑆴𑆮𑆳𑆠𑇀𑆩𑆤𑆳 𑆯𑆴𑆮𑆨𑆳𑆮𑆳𑆨𑇀𑆪𑆶-
𑆥𑆓𑆩𑆂 𑆥𑆫𑆩𑆼𑆯𑇀𑆮𑆫𑆱𑇀𑆪 𑆥𑇀𑆫𑆠𑇀𑆪𑆨𑆴𑆘𑇀𑆚𑆳𑆤𑆼 𑆱𑆴𑆢𑇀𑆣 𑆍𑆮 𑆠𑆼𑆤
𑆯𑆴𑆮 𑆍𑆮 𑆯𑆑𑇀𑆠𑆴𑆫𑆷𑆥𑆠𑆪𑆼𑆠𑇀𑆪𑆶𑆑𑇀𑆠𑆁 𑆠𑆠𑆯𑇀𑆖 𑆮𑆴𑆯𑇀𑆮𑆫𑆷𑆥𑆠𑆪𑆳
𑆱𑇀𑆦𑆶𑆫𑆠𑆴 𑆤 𑆠𑆶 𑆯𑆴𑆮𑆯𑆑𑇀𑆠𑇀𑆪𑆾𑆫𑇀𑆨𑆼𑆢𑆂 𑆯𑆑𑇀𑆠𑆴𑆩𑆠𑆾𑆂 𑆑𑆴𑆁𑆫𑆷𑆥𑆁 𑆯𑆴-
𑆮 𑆍𑆮𑆼𑆠𑇀𑆪𑆳𑆲 𑆤𑆴𑆘𑆯𑆑𑇀𑆠𑆴𑆩𑆳𑆲𑆳𑆠𑇀𑆩𑇀𑆪𑆳𑆠𑇀 𑆱𑇀𑆦𑆶𑆫𑆠𑆵𑆠𑆴 𑆥𑇀𑆫𑆑𑆳𑆯𑆯𑆑𑇀𑆠𑆴-
𑆩𑆠𑇀𑆠𑇀𑆮𑆁 𑆥𑇀𑆫𑆑𑆳𑆯𑆩𑆪𑆵 𑆱𑇀𑆦𑆶𑆫𑆪𑆠𑆴 —

[illegible]
[illegible]
[illegible] 𑇅 𑇘𑇖 𑇅

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

𑆱𑆴𑆢𑇀𑆣𑆠𑇀𑆮𑆁 𑆱𑆵𑆠𑇀𑆮𑆤 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆑𑇀𑆫𑆾𑆱𑆴 𑆤𑆨𑆤𑆬𑇀𑆬𑆜𑆤𑆁 𑆬𑆼𑆯𑇀𑆮𑆑𑇀𑆰-
𑆤𑆵𑆪𑆠𑇀𑆮𑆁 𑆩𑆼𑆢𑆼𑆤𑆴𑆪𑆶𑆑𑇀𑆠𑆁 𑆇𑆠𑇀𑆑𑆫𑇀𑆰𑆁 𑆱𑆢𑇀𑆨𑆳𑆮𑆴𑆠𑆴 𑆇𑆠𑇀𑆠𑆫𑆠𑇀𑆮-
𑆤𑆼𑆤 𑆍𑆱𑆼𑆮 𑆱𑆫𑇀𑆮𑆨𑆷𑆩 𑆮𑆴𑆓𑇀𑆫𑆲𑆼𑆤𑆼𑆮 𑆥𑆫𑆩𑆠𑆠𑇀𑆠𑇀𑆮𑆱𑇀𑆠-
𑆥𑆱𑆶 𑆱𑇀𑆮𑆑𑇀𑆰𑆱𑆲𑆼𑆱𑇀𑆮𑆫𑆥𑆷 𑆱𑆠𑇀𑆪𑆁 𑆤𑆨𑆷𑆩 𑆬𑆼𑆥𑆪𑆼𑆤 𑆠𑆥𑆪-
𑆠𑆠𑇀𑆠𑇀𑆮 𑆠𑆥𑆱𑇀𑆮𑆫𑆷𑆥𑆼 𑆮𑆠𑆼𑆠𑇀𑆮𑆁 𑆱𑆷𑆠𑇀𑆫 𑆬𑆥𑆱𑆤𑆥𑆑𑇀𑆮𑆤𑆵𑆪𑆼, 𑆍-
𑆱𑆴𑆢𑇀𑆣𑆼𑆮 𑆏𑆠𑆮𑆴𑆑𑆸𑆠𑇀𑆪 𑆱𑆫𑇀𑆮𑆼𑆰𑆁 𑆱𑇀𑆮𑆤𑇀𑆢𑆼𑆮 𑆱𑆴𑆮𑆂 𑆱𑆖𑆫𑆷𑆥𑆱𑆴-
𑆠𑇀𑆠𑆂 𑆱𑆫𑇀𑆮𑆨𑆷𑆩𑆬𑆼 𑆱𑇀𑆮𑆳𑆱𑆴𑆱𑆴𑆠𑆴𑆠 𑆅𑆠𑆴 𑇆 𑇒𑇐 𑇆
𑆍𑆮𑆁 𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆠𑆼𑆤 𑆱𑆷𑆩𑆼 '𑆱𑆫𑇀𑆮𑆱𑆩𑆳𑆠𑇀𑆪𑆁 𑆮𑆴𑆯𑇀𑆮' 𑆅𑆠𑆴
𑆍𑆑𑇀𑆰𑆼𑆤 𑆱𑇀𑆮𑆑𑇀𑆰𑆤𑆁 𑆱𑇀𑆮𑆠𑇀𑆮𑆱𑆩𑆖𑆳𑆫𑆱𑇀𑆑 𑆱𑆠𑇀𑆠𑆶𑆥𑆼𑆪𑆼𑆟𑆵 𑆠𑆮-
𑆱𑆵𑆲𑆤𑆁 —

𑆇𑆢𑇀 𑆢𑇀𑆮𑆽𑆠𑆮𑆴𑆑𑆬𑇀𑆥𑆘𑆳𑆬𑆁 𑆱𑆶𑆮𑆴𑆬𑆓𑇀𑆤𑆁 𑆨𑆼𑆢𑆴𑆤𑆵
𑆱𑆠𑇀𑆪𑆳𑆪𑆳𑆁 𑇅 𑆱𑆬𑆴𑆬𑆼 𑆱𑆬𑆴𑆬𑆁 𑆑𑇀𑆰𑆵𑆫𑆼 𑆑𑇀𑆰𑆵𑆫-
𑆩𑆴𑆮 𑆱𑇀𑆦𑆶𑆫𑆴 [illegible] 𑆬𑆪𑆵𑆨𑆷𑆠𑇀𑆮𑆳 𑇒𑇐

𑆍𑆠𑆼𑆤 𑆱𑇀𑆦𑆶𑆫𑆟𑆼 𑆱𑆫𑇀𑆮 𑆠𑆠𑇀𑆠𑇀𑆮𑆥𑆫𑆴𑆩𑆵𑆬𑆤𑆓𑆶𑆟 𑆢𑇀𑆮𑆽𑆠-
𑆮𑆴𑆑𑆬𑇀𑆥𑆘𑆳𑆬𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆁 𑆮𑆴𑆬𑆵𑆤𑆠𑇀𑆮𑆁 𑆨𑆼𑆢𑆴𑆤𑆵
𑆱𑆫𑇀𑆮𑆁 𑆱𑆶𑆮𑆴𑆬𑆓𑇀𑆤 𑆍𑆮 𑆱𑇀𑆦𑆶𑆛𑆁 𑆠𑆠𑇀𑆱𑆫𑇀𑆮𑆤𑆶𑆥𑆩 𑆱𑇀𑆦𑆶𑆫𑆠𑆴
𑆱𑇀𑆮𑆨𑆳𑆮𑆢𑆼𑆮 𑆱𑆫𑇀𑆮𑆩𑆼𑆮 𑆮𑆴𑆱𑆸𑆱𑇀𑆛𑆾𑆃𑆥𑆴 𑆱𑆁𑆑𑆾𑆖𑆥𑆩𑆳𑆬𑆼𑆤
𑆱𑆩𑆱𑇀𑆠𑆼𑆤 𑆱𑇀𑆦𑆶𑆫𑆵 𑆱𑇀𑆦𑆶𑆫 𑆱𑆁𑆘𑆤𑆱𑇀𑆦𑆶𑆛𑆼 𑆥𑇀𑆫𑆬𑆼 𑆱𑆴𑆢𑇀𑆣-

𑆱𑆁
𑆱𑇀𑆠𑆾
𑆛𑆵
𑇓𑇒

[illegible] भलिलिभा

[illegible]

[illegible] ।५०। [illegible]

[illegible]

[illegible] ॥ ५१

[illegible]

लोकद्वयद्वारभूतं य इह विहितमप्यप्रतिष्ठः,
इत्यत्र लब्धमप्युद्धरणधनलवं ददुः ५८
यद्भूमण्डले सिद्धमाविनि कृतं तल्लकमनकल्पितः
लोकद्वयद्वारभूतं परस्परभयीभाविहितं सम्यग्वस्तुरूपं भयं
लब्धाद्ये भुवननायक जितमप्यप्युद्धृत्य भवेद्यः प्रतिष्ठः
मङ्गः परस्परं नियतवृत्तं भूतलेप्रतिष्ठाय धनः धन-
लवं भूयस्तु महेन यत्तः संसारक्लेशसङ्गे भवति नभूतः
भूमौ भेदवत्त्वे विनाशितं उद्धरणधनं दत्तं स्वरूपवत्
प्रेमी सन्ततं भूयस्तमेति ।५८। एवमप्युक्तेऽपि च-
इत्यपि कर्मणि स्थानविहितमस्य कीयत्तु नाशयेत्-
पङ्कजकल्पनिभिमिदं उद्धरणधनं कुमपि,
सिद्धसिद्धिभवतुल्यं नष्टमपि विज्ञानमभिव-
मत्य ५९
पङ्कजकल्पे तृष्णाभूमण्डले तस्मिन् यज्ञं परस्पर-
स्वरूपं कर्मणानुगतं उपभूतनय यत्तिमिदं श्रीमद् इ-
त्थितं ज्ञानमभिवमतमिमिन्द्रज्ञानमभिवमनेनष्टमिति पङ्क-
भव परं भक्तिः तृष्णाभूमण्डले भवे विज्ञानं स्पष्टं,
यः प्रेमः परस्परेण भूतवमननाशं सङ्गमहत्तमनेन

यत्तु किञ्चिदत्र स्वसंवित्तितुल्यमिव यत्स्वसंवित्ति
तुल्यं तत्सर्वं भवति बुद्धौ [illegible] [illegible] तदेव [illegible]
[illegible] भूमौ [illegible] भवति [illegible] भूल-
यत्नपरस्ताद्दि [illegible] 'यदेतंमि भासि [illegible]
[illegible] [illegible] [illegible] ५५॥
न केवलं बुद्ध्याकमस्तत्र [illegible] यत्पर्ति-
[illegible] [illegible] पठितः पद-
[illegible] —

ज्ञानं बुद्धौ तदपि न कुलाय [illegible] क-
[illegible] । [illegible] [illegible] शिवशक्तिः [illegible]
[illegible] ः ५

[illegible] तदपि [illegible]
[illegible]
[illegible] पठितः [illegible]
[illegible] ः ।
तदपि [illegible]
[illegible]
[illegible] ः [illegible] पुनः
प० [illegible]
म० [illegible] कश्च
ली०
३ण

[illegible] ॥ ५० ॥

[illegible] —

[illegible]

[illegible] ५१

[illegible]

[illegible] । ५१ ।

[illegible] —

[illegible] । ५२ ।

[illegible]

55

[illegible]

35

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

नमस्तस्मै परिमितस्वस्वरूपाय गुरुभक्तो न पुनः प-
रमात्मसंवित्तत्त्वं एवं किञ्चित्संभवति इति उक्तनाशे त-
त्त्वं किञ्चिन्नश्यति निजमेव स्वरूपं प्रविशति एतदेव
विष्णुधर्मेष्वप्युक्तं ' यथेतरपानकाणुद्रियते न मन्त-
स्वरूपम्, सत्येव नीयते ध्यानिमताः संभवाः सतः ॥
चित्ते नष्टे यथा वायुर्नैव स्तः सत्यवायुना, स्त्री स्वरूप-
पदार्थं सम्यक् स्वरूपेणोपलभ्यते इति । ० ।
एवं स्वस्थीभूतस्य स्वस्थानगते स्वस्थाने परतत्त्वे शरीरम-
पि पतत्यत्र इति वक्ष्यति —
चित्तं स्वस्थानगतं नत्वा सत्त्वदः परामृतहृत्तिः
स्वस्थीभूतं स्वरूपं विलयेन, ध्वंसे सतः ॥
शरीरसंवित्तेऽपि स्वस्थानस्थे, निजे शरीरस्य हृदि भागेन वायौ
लीनेऽपि सतो विकल्पस्य शक्तिर्वेद्यं नव विलयेन
एव गतः कथं स्वरूपं गतः, ध्वंसे सतः शून्यादि दृष्टि चित्ते-
पि चित्ते विलीनेऽपि स्वस्थानरूपे शक्तिस्वरूपं हृदयं प्रति सम-
स्ते सिद्धहृदि भावरूपे गतं येन स एवं वदन्ति सत्त्वदः इति,
स एव न ध्वंसमयः परामृत हृत्तिः परम हृदयस्थान-
लक्षणहृत्तिः हृदयरूपस्यैव येन सत्यतीति एवं परिशील-
नेन स्वस्थीभूतानि पञ्च पञ्चानि विलीनानि संस्कारस्य सि-

पृ० स० ली० ८-

एवं [illegible] विकल्पा अपि [illegible] कथङ्कारं [illegible]-
[illegible] —

[illegible]
[illegible] भवति ॥ १८ ॥

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥ ७३ ॥
[illegible]
[illegible]
[illegible]
[illegible] —
[illegible]
[illegible]
ल कलन [illegible] कलन [illegible] मूष्य
[illegible]
[illegible]
[illegible]

निवर्भे
वः

५ -
म॰
ली॰
८३

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ।१०।

[illegible]
[illegible]
[illegible] १०

[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ।१३।
[illegible]
[illegible]
[illegible]
[illegible] 13
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ।१३
[illegible]

[illegible]

[illegible]

[illegible] ॥

[illegible]

[illegible]

११

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

'कष्टकल्प' इति तथैवैतत्सूत्रमात्रेणानभ्युपगन-
स्यैव नैसर्ग इति ।१८।

इदमत्र सूत्रमिदम् —

सर्वं समयसामर्थ्यात् यद्भाति यस्य संविदः सतः ।
विश्वस्मात्मानिरूते विभूत्यापह्नुतकल्पनाक-
लितस्य ।१९। विश्वस्य समयप्रत्ययं निरुक्त-
ते वक्तृप्रतिपत्तृकल्पनाभिः, समयति स यत्रैत-
त्सूत्रस्य सङ्केतं समर्थं स ।२०।

एवं यत्रस्थस्य सामर्थ्यमित्युक्तं स्वतःसिद्धं सम्बन्धस-
मभ्युपगन्तव्य नियमः कीदृशं इत्यत सङ्केतं स-
लक्षणमिति सम्बन्धः तत्त्वेन प्रतिपादिकाया मन्त्रेऽप-
यथार्थं तद्रूपं प्रमेयस्य रूपं लक्षणं लक्षणः
सङ्केतं तत्र भावेन तदभिसन्धिस्वरूपाणामनि-
यमादिश्रीकरणकल्पनं स विना लक्षणं लक्षणः सम-
यमादिश्रीकरकल्पनं स विना लक्षणं लक्षणः सम-
र्थं स किं सूत्रमिदम् समयमिदमिति यत्र चमिदम्पू-
र्वं स किं सूत्रमिदम् सवमिदमिति यत्र च भिन्नपू-
र्तिकं तत्र वस्तुभूतं युक्तं तत्र तत्त्वपरिमील-
नेन तत्र समयमिदमेकः सूत्रमिति समीकृत
यत्र तत्त्वतीत्य 'समयसूत्रमभ्युपगन्तुं समयकृतं नि
सर्गात्, इत्यत्र येन प्रकारेण समयसमर्थनं इ-

𑆱𑆳𑆤𑆩𑆷𑆱𑇀𑆠𑆷 𑆪𑆢𑇀𑆧𑆢𑇀𑆩𑆩𑆷𑆪 𑆠𑆢𑆩𑆴𑆠𑆶 𑆱𑇀𑆠𑆶 𑆱𑇀𑆠𑆶𑆩𑆁𑆮𑆴𑆱𑇀𑆠𑆶𑆩𑆶𑆰𑇂
𑆩𑆶𑆱𑆫𑆵𑆫𑆩𑆥𑆴 𑆮𑆼𑆢𑆱𑇀𑆪 𑆓𑆴𑆤𑇀𑆤𑆩𑆴𑆮 𑆟𑆫𑆪𑆠𑇂 𑆩𑆼𑆮 𑆪𑆢𑇀𑆢-
𑆢𑆩𑆢𑆶𑆢𑆼𑆠𑆱𑆥𑆴 𑆮𑆱𑇀𑆠𑆶𑆩𑆶𑆠𑆩𑆳 𑆠𑆣 𑆮𑆼𑆢𑆳𑆪𑆖𑆑𑆑𑆥𑆳𑆬𑆁
𑆫𑆩𑆪𑆠𑆴 𑆱𑆖𑆪𑆠𑆴 𑆪𑆱𑇀𑆪 𑆱𑆢𑇀𑆢𑆴𑆣𑆴𑆰𑆪𑆥𑆳𑆤𑆑𑆬𑆱𑆳
𑆩𑆮𑆢𑆼𑆢𑆱𑇀𑆠𑆶𑆥𑆴𑆩𑆁 𑆮𑆼𑆢𑆁 𑆱𑆼𑆪𑆢𑆑𑆢𑆢𑆁 𑆥𑆴𑆬𑆴𑆑
𑆠𑆴𑆩𑆴𑆠𑆴 𑆪𑆖𑆑𑆁 𑆑𑆢𑆳𑆩𑆶𑆪𑆁 𑆠𑆢𑆼𑆮 𑆑𑆥𑆳𑆬𑆁 𑆩𑆴𑆠𑆼𑇂𑆩𑆶-
𑆱𑆑𑆬𑆁 𑆪𑆢𑆶𑆩𑆪𑆠𑆴 𑆩𑆳𑆫𑆑𑆳 𑆫𑆩𑆼 𑆥𑆬𑆑𑆠𑇀𑆫𑆴-
𑆩𑆷𑆠𑇀𑆫 𑆱𑆩𑆢𑇀𑆢𑆠𑆼 𑆢𑆼𑆠𑆱𑆥𑆴 𑆱𑆢𑆁 𑆱𑆠𑆴𑆤 𑆑𑆴𑆬 𑆑𑆥-
𑆬𑆩𑆶𑆁 𑆮𑆵𑆫𑆥𑆳𑆤𑆁 𑆫𑆱𑇀𑆠𑆼 𑆢𑆼𑆠𑆢 𑆮𑆴𑆱𑇀𑆮𑆫𑆱𑆼𑆠𑆴 𑆮𑆴𑆱𑇀𑆮𑆷𑆩𑆴𑆢𑆼-
𑆢𑆼 𑆱𑆢𑇀𑆢𑆴𑆣𑆴𑆰𑆪𑆥𑆢𑇀𑆩𑆑𑆶𑆥𑆼 𑆑𑆥𑆳𑆬𑆪𑆖𑆼 𑆪𑆼𑇂𑆩𑆼
𑆩𑆳𑆫𑆖𑆟𑇂 𑆱𑆖𑆠𑆩𑆢𑆩𑆪𑆼𑇂𑆱𑇂 𑆩𑆼𑆮 𑆥𑆳𑆩𑆤-
𑆤𑆱𑆳𑆪𑆴𑆢 𑆱𑆩𑆩𑆮𑇂 𑆠𑆶𑆩𑆁 𑆥𑆳𑆤𑆁 𑆠𑆼𑆤𑆢𑆤𑆼 𑆤𑆴𑆖𑆼
𑆪𑆢𑆠𑆁𑆩𑆶𑆠𑇀𑆠 𑆮𑆴𑆱𑇀𑆮𑆱𑇀𑆪𑇂 𑆱𑆑𑆬𑆩𑆶𑆤𑆵𑆪𑇂 𑆑𑆖𑆼𑆤𑇂-
𑆱𑇂 𑆥𑆢𑆑𑆬𑆥𑇂 𑆩𑆼𑆮 𑆑𑆥𑆳𑆬𑆁 𑆠𑆤𑇀𑆤𑆠𑇂 𑆩𑆳𑆫𑆖𑆟𑇂
𑆱𑆩𑆢𑇀𑆢𑆳𑆱𑆩𑇂 𑆱𑆶𑆑𑆱𑆳𑆪𑆴𑆢𑆢𑆤𑆩𑆴𑆠𑆴 𑆑𑆥𑆳𑆬𑆁
𑆠𑆶 𑆱𑆠𑆴𑆤𑇂 𑆑𑆫𑆟𑆠𑆁 𑆖𑆮𑆠𑆵𑆢𑆢 𑆤𑆴𑆬𑆑𑆫𑆟𑆠𑆩𑆴𑆠𑆴
𑆤𑆴𑆫𑇂 𑆱𑆴𑆢𑇀𑆢𑆵𑆪 𑆪𑆼𑆑𑆳𑇂 𑆱𑆑𑆫𑆱𑆴𑆑𑆳 𑆢𑆼𑆮𑆵𑆱𑆖-
𑆮𑆢𑇀𑆢𑆴𑆤𑆱𑆵𑆱𑆪𑇂 𑆠𑆼𑆰𑆖𑆼𑆢𑆱𑇀𑆪 𑆠𑆢𑆼𑆢𑆳𑆪𑆖𑆑𑆁 𑆮𑆴𑆣𑆪-
𑆢𑆶𑆁𑆤𑆱𑆶𑆢𑆵𑆠𑆴 𑆤𑆴𑆬𑆑𑆫𑆟𑆁 𑆪𑆢 𑆥𑆳𑆬𑆴𑆩𑆶𑆤 𑆑𑆥𑆳𑆬𑆼𑆤
𑆥𑆳𑆤𑆁 𑆥𑆵𑆪𑆠𑆼 𑆠𑆢𑆼𑆮 𑆮𑆼𑆢𑆳𑆪𑆖𑆑𑆑𑆥𑆳𑆬𑆼𑆤 𑆮𑆴𑆱𑇀𑆮𑆫𑆩-

अ[illegible]स्थानं यः कश्चिज्जीवन् [illegible]ज्ञानतः सम[illegible]-
[illegible] नियम[illegible] –
[illegible] स्थानं [illegible]
[illegible] यो वेत्ति स [illegible] भवति । ३४
अ[illegible] [illegible]-
[illegible] परिमीलन[illegible]-
[illegible] यो वेत्ति यः कश्चिदेव [illegible]
[illegible]: [illegible]
[illegible] नियमः यतो यो [illegible]-
[illegible]-
[illegible] भवति [illegible]:
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]:
[illegible] इति [illegible] स्थानं [illegible]: स-
व: सि[illegible] इति ॥ ३४ ॥
एवम् [illegible]: शरीराणि [illegible]
[illegible] शरीरं परित्यज्य [illegible] प्रति-
पद्यते –

[illegible]

33

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥३३॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] । ५८ ॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

37

पु-
भ-
ली-
५१

𑆟𑆮𑆳𑆱𑇀𑆠𑆴 𑆑𑆴𑆁𑆠𑆶 𑆨𑆳𑆮𑆳𑆨𑆳𑆮𑆪𑆾𑆫𑇀 𑆨𑆷𑆠𑆠𑇀𑆮𑆳𑆠𑇀 𑆪𑆡𑆳𑆱𑇀𑆡𑆴𑆠𑆁 𑆮-
𑆱𑇀𑆠𑆶 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆠𑆡𑆽𑆮 𑆱𑇀𑆡𑆴𑆠𑆁 𑆪𑆢𑆱𑇀𑆠𑆴 𑆤 𑆠𑇀𑆮𑆱𑇀𑆪 𑆮𑆱𑇀𑆠𑆶𑆤𑆂 𑆑𑆱𑇀-
𑆪𑆴𑆢𑇀 𑆮𑆴𑆑𑆳𑆫𑆂 𑆱𑇀𑆫𑆶𑆠𑆳 𑆤 𑆥𑆶𑆤𑆂 𑆮𑆱𑇀𑆠𑆶𑆤𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆑𑆴𑆚𑇀𑆖𑆴-
𑆢𑆥𑇀𑆪𑆤𑇀𑆪𑆡𑆳 𑆨𑆮𑆠𑆴 𑆨𑆮𑆼𑆠𑇀 𑆥𑆷𑆫𑇀𑆮𑆩𑇀 𑆌𑆮 𑆑𑆳𑆫𑆟𑆳𑆨𑆴-
𑆮𑇀𑆪𑆑𑇀𑆠𑆂 ।𑇖𑇙।

𑆌𑆮𑆁 𑆩𑆤𑆱𑇀𑆪 𑆱𑇀𑆮𑆫𑆷𑆥𑆮𑆫𑇀𑆟𑆤𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆼 𑆱𑇀𑆡𑆴𑆠𑆼𑆤 𑆥𑆫-
𑆩𑆳𑆫𑇀𑆡𑆱𑇀𑆮𑆫𑆷𑆥𑆼𑆟 𑆤𑆪𑆤𑆼𑆤𑆽𑆑𑆥𑆫𑆴𑆱𑇀𑆥𑆶𑆫𑆂 𑆥𑆫𑆩𑆳𑆫𑇀𑆡-
𑆱𑇀𑆮𑆨𑆳𑆮𑆂 𑆑𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆴𑆥𑆴 𑆤𑆴𑆫𑆪𑆳𑆢𑆴𑆑𑆳𑆫𑆳𑆁 𑆥𑆫𑆴𑆑-
𑆬𑇀𑆥𑆤𑆵𑆪𑆩𑆴𑆠𑇀𑆪𑆳𑆲 —

𑆥𑆫𑆩𑆳𑆫𑇀𑆡𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑆶𑆤𑇀𑆢𑆫𑆁 𑆥𑆫𑆁 𑆩𑆩 𑆨𑆴𑆠𑇀𑆠𑆴𑆁 𑆥-
𑆫𑆥𑆷𑆂 𑆑𑆳𑆫𑆳𑆱𑆶 𑆠𑆴𑆫𑆴𑆠𑆶𑆫𑆴𑆪𑆁 𑆥𑆳𑆫𑆁 𑆤 𑆮𑆼𑆠𑇀𑆠𑆴 𑆤𑆼𑆠𑆶 𑆤
𑆥𑆷𑆫𑇀𑆤𑆳 । 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆩𑆤𑆱𑇀𑆮𑆵 𑆌𑆮𑆁 𑆤𑆳𑆱𑇀𑆠𑆴 𑆤𑆼𑆠𑆶 𑆤
𑆩𑆼𑆠𑆶𑆂 𑇗𑇐 𑆪𑆼𑆃𑆥𑆴 𑆠𑆩𑆱𑇀𑆱𑆾𑆮𑆼𑆤 𑆮𑆴𑆢𑆶𑆂 𑆥𑆫𑆩-
𑆱𑇀𑆪𑆴 𑆩𑆫𑆵𑆩𑆳𑆥𑆳𑆩𑆪𑆂 𑆱𑇀𑆮𑆫𑆷𑆥𑆴𑆩𑆳 । 𑆠𑆼𑆃𑆥𑆴 𑆥𑆫𑆳𑆠𑆤-
𑆱𑆁𑆮𑆴𑆠𑇀𑆱𑆶𑆩𑆁 𑆤𑆳𑆱𑇀𑆠𑆴 𑆪𑆳𑆫𑇀𑆠𑆴 ।𑇗𑇐।

𑆌𑆮𑆁 𑆥𑆫𑆳𑆥𑆳𑆢𑆴𑆠𑆼 𑆱𑇀𑆮𑆫𑆷𑆥𑆼 𑆥𑆫𑆩𑆳𑆫𑇀𑆡𑆂 𑆱𑆳𑆩𑆼 𑆱-
𑆢𑆴𑆤𑆳𑆩 𑆩𑆤𑆱𑇀𑆮𑆵 𑆑𑆬𑆂 𑆥𑆠𑆼𑆱𑆼𑆮𑆳𑆤𑆼𑆤 𑆱𑆩𑆷𑆢-
𑆪𑆩𑆤𑆱𑆮𑆱𑇀𑆮 𑆩𑆩𑆵𑆥𑆱𑇀𑆡𑆼𑆂 𑆥𑆫𑆩𑆳𑆫𑇀𑆡𑆠𑆴 𑆠𑆩𑆴𑆠𑆁 𑆥𑆫𑆁
𑆥𑆳𑆥𑆩𑆪𑆵𑆮 𑆨𑆴𑆠𑇀𑆠𑆴𑆁 𑆥𑆷𑆫𑇀𑆤𑆳 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆱𑆢𑆳𑆩𑆳𑆤𑆴𑆠𑆁 𑆤𑆳𑆱𑇀𑆠𑆴 𑆤𑆳𑆱𑇀𑆠𑆴
𑆥𑆫𑆩𑆳𑆫𑇀𑆡𑆩𑆼𑆮 𑆩𑆤𑆱𑇀𑆮𑆵 𑆌𑆮𑆁 𑆑𑆳𑆫𑆟𑆁 𑆤𑆳𑆱𑇀𑆠𑆴 𑆤𑆳𑆱𑇀𑆠𑆴

𑆃𑆮𑆴𑆨𑆳𑆤
𑆩𑆤𑆳।

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
𑆮 𑆨𑆮𑆠𑆴 𑇆 𑇙𑇙 𑇆
[illegible]

𑆥𑆫𑆩𑆳𑆠𑇀𑆩𑆳𑆤𑆩𑆼𑆤𑆁 [illegible]
[illegible] 𑆮𑆴𑆰𑆪𑆼𑆰𑆶 [illegible]
[illegible] 𑇅 𑆨𑆶𑆮𑆤𑆼𑆰𑆶 [illegible]
[illegible] 𑇅 𑇑𑇐𑇐 𑇅

[illegible] 𑆮𑆽 [illegible] 𑆨𑆶𑆮𑆤𑆼𑆰𑆶 [illegible] 𑆨𑆮𑆠𑆴 [illegible] 𑆮𑆴𑆰𑆪𑆼𑆰𑆶 [illegible]

एवमनेन स्तनयित्नुमेल्ल लत्त्वेस्मनापि सत्सु-
सु सत इय विकृतेऽस्मिन् यः प्रवृत्तो न पश्यति तस्मा-
त्सर्वस्मिन् शिवैकमूर्तिमये ननु सा निपतति स-
वर्णेनेष्टं भाति निरूपयति —

तस्मात्समस्तं शिवमिति यः कश्चिदस्ति स
शिवतुल्या । इति सत्यं परमार्थो यथा तथा-
पि प्रयतनीयम् ॥ १३ ॥

अत एवं सर्वस्वभावप्रसरणम् प्रतिपादितवसत्त्व-
तुमण्डलतः तस्मादभिन्नमेवेन सान्ते प्रवृत्त-
भक्तिप्रत्यक्षे पश्य यः कश्चिन्निरत उत्पत्तिकारि नि-
यमस्वः प्रमितः यः कश्चिल्लने ननसा-
ष्टष्टणि ज्ञानसत्पारिपीठिते निरते शिवैकवृत्तौ निः-
नमेल्य गतः तत्रैव प्रमाणेन कृतं निमग्नः सन्तुग-
शिरल्लभ्यनैव कलेन शिवत्वभाति सकलसंस्मारि-
कल्पितसनवप्रय पासूयेतुपदसभक्तेनैव सन्मन
प्रवृत्ति यथा शिवणदेऽपि सम्भृ "इत्येकशिवके
भेक एषत वद्गीकृतम् । मनेकशिवक भक्ति-
स्वतः कृत वदत" इति सत्य एवं शिमपह तस्मि-
न्नसत्यं यथा तथा येन तेनापि प्रकारेण प्रयत-

𑆤𑆵𑆪𑆁 𑆥𑇀𑆫𑆑𑆸𑆠𑆼— 𑆱𑆩𑆱𑇀𑆠𑆩𑆂 𑆑𑆢𑆂 𑆥𑇀𑆫𑆟𑆮𑆼 𑆪𑆤𑇀𑆠𑇀𑆫𑆂 𑆑𑆬-
𑆮 𑆤𑆴𑆂𑆯𑆧𑇀𑆢 𑆱𑆫𑇀𑆮𑆘𑇀𑆚𑆾 𑆱𑆠𑇀𑆠𑆳𑆥𑆢𑆮𑆬𑆼𑆥𑆼 𑆤 𑆤𑆴𑆫𑇀𑆟𑆪𑆂 𑆯𑆶𑆢𑇀𑆣-
𑆪𑆾𑆓𑆳𑆠𑇀𑆩𑆑𑆼𑆤 𑆱𑇀𑆮𑆱𑇀𑆮𑆫𑆷𑆥𑆼 𑆯𑆴𑆮𑆼 𑆱𑇀𑆮𑆫𑆷𑆥𑆼 𑆯𑆴𑆮𑆁 𑆠𑆂 𑆱𑆩𑆵-
𑆫𑆴𑆠𑆁 𑆤𑆳𑆠𑇀𑆩𑆤𑆴 𑆱𑇀𑆡𑆴𑆠𑆼 𑆑𑆫𑇀𑆠𑇀𑆫 𑆥𑇀𑆫𑆱𑆴𑆢𑇀𑆣𑆴𑆂 𑆅𑆠𑇀𑆪𑆥𑆴 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆱𑇀𑆪
𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆩𑆳𑆠𑇀𑆩𑆪𑆾𑆓𑆮𑆯𑆳𑆠𑇀 𑆥𑇀𑆫𑆠𑇀𑆪𑆼𑆑𑆮𑆬𑆼𑆤 𑆥𑇀𑆫𑆠𑇀𑆪𑆥𑆴 𑆪𑆾𑆓-
𑆱𑇀𑆠𑆱𑇀𑆪 𑆅𑆠𑆴 𑆪𑆾𑆓𑆼𑆤 𑆥𑆫𑆴𑆩𑆵𑆬𑆤𑆳𑆠𑇀 𑆯𑆴𑆮𑆠𑇀𑆮𑆁 𑆑𑆵𑆫𑇀𑆠𑆴-
𑆠𑆂 𑆱𑆩𑆥𑆢𑆩𑆴𑆠𑆴 𑆥𑆫𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆩𑆳𑆠𑇀𑆩𑆤𑆂 𑆱𑆠𑇀𑆠𑆳𑆁 𑆱𑆠𑇀𑆠𑆳-
𑆥𑆢𑆮𑆬𑆼𑆥𑆼 𑆤 𑆑𑆢 𑆅𑆠𑆴 𑆯𑆴𑆮𑆩𑇀 𑇅𑇑𑇐·𑇓𑇅

𑆍𑆮𑆁 𑆱𑆩𑇀𑆥𑇀𑆫𑆑𑆳𑆫𑆂 𑆱𑆽𑆮 𑆠𑆶𑆫𑆑𑆼𑆤 𑆥𑆫𑆩𑆳𑆠𑇀𑆩𑆤𑆼-
𑆥𑆢𑆼𑆤𑆁 𑆯𑆴𑆮𑆠𑇀𑆮𑆩𑆳𑆠𑇀𑆩𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆁 𑆱𑆠𑇀𑆠𑆳𑆩𑇀𑆠𑆮𑆟𑆩-
𑆱𑆠𑇀𑆠𑆳𑆩𑇀 𑆥𑇀𑆫𑆠𑆴𑆥𑆳𑆢𑇀𑆪 𑆱𑇀𑆮𑆱𑇀𑆡𑆂 𑆥𑆳𑆫𑆴𑆯𑆼𑆰𑆳𑆠𑇀 𑆘𑆴𑆠𑆪
𑆱𑇀𑆮𑆳𑆠𑇀𑆩𑆤𑆂 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆥𑇀𑆫𑆮𑆑𑆩𑆥𑆢𑆩𑆼𑆮𑆥𑆢𑆼𑆤𑆂 𑆥𑆳𑆯-
𑆫𑆷𑆥𑆩𑆳𑆠𑇀𑆩𑆤𑆼 𑆥𑆢𑆂 𑆅𑆠𑆴 𑆤𑆴𑆫𑆶𑆥𑆪𑆤𑇀𑆤𑆶𑆥𑆱𑆁𑆲-
𑆫𑆠𑆴—

𑆱𑆠𑇀𑆪𑆳𑆤𑆤𑇀𑆢𑆔𑆤𑆁 𑆯𑆴𑆮𑆁 𑆥𑆫𑆩𑆁 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆥𑇀𑆫𑆠𑇀𑆪𑆪𑆂 𑆥𑆫-
𑆩𑇀 𑇅 𑆤𑆳𑆩𑆽𑆮𑆽𑆮 𑆯𑆴𑆮𑆠𑇀𑆮𑆁 𑆤𑆴𑆘𑆫𑆷𑆥𑆩𑆮-
𑆱𑆩𑆼𑆠𑆴 𑇅𑇑𑇐·𑇔 𑇆

𑆅𑆢𑆁 𑆥𑇀𑆫𑆡𑆩𑆁 𑆯𑆴𑆮𑆱𑇀𑆪 𑆥𑇀𑆫𑆠𑆴𑆥𑆳𑆢𑆴𑆠𑆁 𑆪𑆢𑇀𑆮𑆠𑇀 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆁 𑆥𑇀𑆫-
𑆠𑇀𑆪𑆁 𑆢𑆫𑇀𑆯𑆤𑆁 𑆮𑆴𑆯𑇀𑆮𑆩𑆠𑇀𑆮𑆁 𑆱𑇀𑆮𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆥𑇀𑆫𑆠𑇀𑆪𑆪𑆂
𑆱𑆠𑇀𑆠𑇀𑆮𑆩𑆼𑆮 𑆱𑇀𑆮𑆫𑆷𑆥𑆁 𑆥𑇀𑆫𑆠𑇀𑆪𑆑𑇀𑆰𑆩𑆳𑆠𑇀𑆩𑆠𑆠𑇀𑆠𑇀𑆮𑆁 𑆯𑆴𑆮𑆠𑇀𑆮𑆁

[illegible]

[illegible]